No 795

RESEARCH LIBRARY 795 J. & K. GOVT. SRINAGAR

[illegible]

[illegible]

[illegible]

सभंगप्रज्ञापकेनापि ज्ञापितत्वं सभंगत्वमिति, तत्प्रतिष्ठा सभंग
प्रज्ञापकेनापि ज्ञापितप्रतिष्ठा सामान्यस्य भंगत्वमत्रभा। एतेन
सोपि प्रत्युक्तः सामान्यस्य भंगत्वेपि भुवे। भंगत्वविषयत्वमपि
सत्त्वादुभयः सामान्यस्य तदेकस्य सत्त्वात्। तत्प्रतिष्ठा सभंगप्र
येव युक्तः। यत्प्रतिष्ठा सभंगस्य सर्वैकरूपत्वैकस्य
गतिः। विकल्पेन तत्तद्वचनविषयत्वापत्तेः। तथा त्रुटिरप्र
त्यक्षेण सेप्रसक्तः स्वरूपप्रतिषेधः सामान्यस्य द्रव्यमित्यादि
स्वरूपसामान्यविशेषस्य प्रसक्तस्य भेदविकल्पः सामान्यविशेष
कल्पवत्रिविकल्पे नानुगतः, नवमविकल्पप्रतिष्ठा सामान्यत्वः। त्रि
विकल्पद्वयस्य त्वसंभवात् प्रतिष्ठितत्वाभावात्। एवं तत्त्वः प्रथ
मस्त्वभावस्य सामान्यनैकान्तैकरूपप्रतिषेधरूपे प्रश्नवशः। पु
नः प्रतिष्ठा स्वयं। सतुपपत्त्वेन वैचित्र्यादिकमादौ, एकमिद्धं
स्वरूपस्य सामान्यविकल्पनविधेरिवसिद्धत्वाद, ध्रुवत्वमिद्धस्य
सामान्यविशेषप्रतिवादेनाशुद्धस्य पर्यनविशेषप्रसिद्धस्य
वचनस्य द्वैविध्यात् उत्कृष्टविशेषस्य प्रतिष्ठितत्वं विरुद्ध
प्रतिषिद्धस्य सिद्धत्वं परीक्षे नैकपदेस्य। धर्मिणः सामान्य
स्य नैकैकस्य रूपः संभवः एव सत्त्वसम्भवस्य प्रतिषेध इति
नामस्वरूपमिति। केवलमियत्त्व अस्तु। यस्यैकस्मिन्धर्मे
नानाकल्पनेव स्वरूपसिद्धिः कार्यस्य सत्त्वः स्वरूपः, यावतां
स्वरूपैः सामान्यधर्मप्रश्नः सत्त्वस्य नानात्वे धीः, एकस्मि
स्वरूपे सप्तैकार्येव सवैविधिः। यत्स्वरूपस्य सत्त्वः स्वरूपः
यावन्तः सत्त्वसमवेतस्य सत्त्वः। यत्प्रश्नवशात्
स्वरूपः सत्त्वः, विधिप्रतिषेधविकल्पे सत्त्वा, प
क्षसत्त्वं यत्सामान्यस्य संवेदनाप्रतिषेधप्रतिष्ठा सत्त्वप

सप्तभंगत्वः। विशिष्टसत्यं प्रश्नः प्रत्येकस्य, तदा सत्त्वः कश्चि
त्, तदपि कश्चित्तद्धर्मसत्ता सप्तभंगोपि तत्रास्ति सत्त्व
स्वरूपः संभवेत्। उपकार्यप्रकारयोः सामान्यविशेषयोः सत्त्वे विशि
ष्टरूपः, सप्रतिपादनीयत्वमेव, तत्प्रतिपादनेनैव एकत्र
प्रकारयोः भूमिकयोः समप्रत्येक प्रतीतिहेतुनोपचारेनासमत्वान
प्रत्येकसत्त्ववचनलेपः स्वरूप, नैकप्रकारप्रकारयोरपि स्वरूपीनः
कश्चित्प्रकारः सप्रतीतिप्रतिष्ठितत्वमेव विभूतिता। तत्र सि
द्धयोः सत्त्वस्य सामानाधीयया सत्त्वप्रतिषेधप्रकारप्रकारत्वं
ऽनेकज्ञानप्रयत्नयोः सत्त्वयोः प्रत्येकयोः भूमिकयोः स्वरूपः प्रकृत
येनैकप्रकारभङ्गानुयोगित्वानुपपत्तेः समप्रत्येकप्रकारसंग्रहत्व
सिद्धये सिद्धये विप्रतीयत इति, न कारणमेकं न, सप्तसत्त्वे
येत्यवती, नानानां वचनानां किमेकैकस्य सत्त्वेनैकस्मिन्
नपत्त्व किं वा वचनानां समष्टि एकस्यैकैकेन। तद्यदेकैकस्मिन्नेक
सत्त्वे प्रतितिष्ठेत, एकसत्त्वेव प्रकारभङ्गत्वमस्तु॥ अथानेकप्रकार
भङ्गविषयत्वैकप्रकारभङ्गविषयाः, तत्र प्रथमः, तत्र प्रतिष्ठ
स्वरूपमात्रस्य सिद्धत्वे प्रतिष्ठेनैकत्वापि प्रकारभेदे तामुक्तु
त्तः सप्तभावः, तत्तमि सप्तसत्त्वोपपत्तेः, एकप्रकारभङ्गानुयोगि
सप्तानेकेवती, तत्र सप्तप्रकारस्य स्वरूपेण कार्यः, प्रत्येकस्य भुस
प्रत्येकस्य ऽतिप्रसंगात् सत्त्वस्य प्रतीतिसिद्धत्वे प्रतिषेधेन प्रकृत
स्य, प्रत्येकः प्रतीतिसिद्धत्ववती, नत्वन्यस्य कस्यचित्प्रतिषेधस्य भा
वेनानेकसत्त्वैकस्य स्वरूप। तत्र सत्त्वानां सत्त्वप्रकारस्य विधेयत्व
स्वरूपत्वप्रत्येकस्य सत्त्वं तत्त्वं, ऽन्यत्वस्य प्रतीतिमात्रस्य सत्त्वप्रत्ये
कस्य नैकप्रकारभङ्गविषयत्वं प्रतिपादयितुं स्वरूपात्मनां प्रत्य
क्षानुभवप्रतिसिद्धत्वात् प्रतिष्ठा सप्तभङ्गावस्थायाः सप्तत्वः, तत्र
सप्तप्रत्येकस्वरूपाऽन्यत्वं तत्त्वं विनाप्रतीतिस्वेन सत्त्वेकत्व

मत्वात्, विशेषणी [illegible] इत्यर्थ [illegible] पदमेव, [illegible]
[illegible] संबन्धे [illegible] अवच्छेद [illegible]
यत्, [illegible] नयत्वात्, [illegible] तस्मात् [illegible]
[illegible] अवच्छेद [illegible] इति ॥ ॥ [illegible]
[illegible] अवच्छेद [illegible] नः [illegible]
[illegible] प्रतियोगिता [illegible] अवच्छेद [illegible]
[illegible] अवच्छेद [illegible] कयेः [illegible]
[illegible] नैक [illegible] इत्यर्थः
[illegible] कल्पना यत्नेकल्पना [illegible]
[illegible] ॥ [illegible]
[illegible] किन्तु [illegible]
[illegible] नैक [illegible]
[illegible] नयेष्वभा, [illegible]
[illegible] विषये
[illegible] कारणत्व [illegible]
[illegible] विकल्प [illegible] विकल्प [illegible]
[illegible] नैक [illegible]
[illegible] विशेष [illegible] विशेषणे:
अवच्छेद [illegible] विशेष
विशेषणे: [illegible] विशेषणा [illegible]
[illegible] अवच्छेद [illegible]
[illegible] अवच्छेद [illegible]
[illegible] विशेष [illegible] विशे
[illegible]
अं॰ मि॰ योगिना [illegible]
८ [illegible] अवच्छेद [illegible]
[illegible] अवच्छेद [illegible]

[illegible] नपरंतु [illegible]
[illegible]
[illegible] अवच्छेद [illegible] ॥ [illegible]
[illegible] अवच्छेद [illegible] ॥ ॥ ॥
[illegible]
ये ॥ ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible]
[illegible] ॥ [illegible]
[illegible]
[illegible]
[illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] आधेय [illegible]
[illegible] ॥ [illegible]
[illegible] आधेय [illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] आधेय [illegible]
[illegible]
[illegible]

त्रुपायायेष्ठेलः कादृतेगाः इनत्तु उमभाकृतृभाभाञुमिवेत्नि
तेति, एवंसज्ञनाउत्रमातिउत्कुलाविमुक्तबेवीअल्का मिक्ताउपि
लीपवानिर्दृमिताभातु श्रूक्रमेतु श्रुतुपिली हगाभतिवरोतुल
पदृतुस्वेवी चञलकुउत्रापकरेपानाउपिलंउत्तः ज्ञगतरक
लीमउगुभृत मतिजस कुतुपाः विधानउडिअभ्यतुपंपवाप
ताउ भानुनेकुतुपडउिभुलतुपंसापवाभितिउिपाचतभामतिविधा
ष्टकैवहृङ्क कतुनध्रुश्रुपडयाविलायुउ, भनुलक्तुभिंष्टाप्रव
नाःउभावपानंतंनियउपुवरुभानाभवाल्ज्ञननी, उभानेकुप
भेकेवाविलायउं, प्रतिपश्रुपतिभेपाहनजलभापकुतुवरुभव्वर
वैकरूकुउाभाप्रूतुनविसृभुउाभा, दूगीनश्र कालप्रूपानकुउ
प्रूषभउः मतिजेवश्रलउप, प्रूभमभुउत्तृतुवः, भुतष्टमेत्र
घः, यथाभुल्पविषयेनिभक्तविषयञुतृकुतेवाउ, उउिवि
लायत्रजाप्रूभाजावप्रतिपत्तेवाउ पउभुवानिरूमःवृउः॥ ८॥
एवंडिविपंस्वेवीभंभुयप्रुलक्तुउसाभुवतुपंपवाभूहुभाक॥॥
पदृतुनप्रीपदृतिवनविरुणमकोउ मृकोउ एपमतीमकूपी
यभकोतुभपत्रूभकधुलायमनिकोउ॥ भाभ्केभकोउ
विलायउउविज्ञाजः, पक्तुयथाभिमतृपुभा पदृतुंपाक
प्रूभाविकायष्टानःभाक्रूष्टुभक्तऊवः, उभुलिउतुउ
विभक्तमतिजाउलमकावेतृजाद्वःभावभुभामाउउभूतु
उमपुनतुभिकवभानक्तुउपंसधितुमज्ञानावंमहुउःम
नभुलयभुमेविलायउं, वाज्ञानुभाभुपमहुदेउर्हुसेबा
वनिकोउउ, किंतमकालए्ठिवज्ञानं नेयटेनवमेतभकी
उभवामासष्टकेननिलाकुपे प्रापकतूतवाष्टतेनवृ
उभाक्त्रूभाविकाया पनिकोः, यवहितिजूलतूलनकःभुउव
नी, नकितृक्तमवक्तुउनंवभवाः प्रूति नकिंमिमेवकनानं
ववलवां प्रूतीति, वडज्ञात्रमृतकुल यहुपवाविकंप्रूकुल
उतेनेनेवउपयुक्तलीयिउ, केवीयभिक्तभुवभुउः प्रभुदुतु
यनयप्रथावप्रतिति॥ मउउकुमृतनीपात्तान्तुष्टतृ

भ॰ त॰
८

पति, पदृतुनंयःपविक्तिजीयकुभिकायिमायोउत्रुभियपप्रुपः पदृत
प्रवविःप्रतीश्रुमृजनं, यवाक्रप्रतिक्तिजूलकाउ भवमंविचमीकेमुलिव
विमुगितिभुयो नमःप्रुभाशृवष्मेभिवसेत्रुभित्रुवउउ॥ पवज्ञा
नंभसमक्तवेउमंनीलभिंपीउभितिप्रतीकम्भवभ्रूयाभिमभि
कुभितिनिक्तुयज्ञनंपदृतः॥ यथीउं भवंकक्तोपिलंपाकुलनेपाउ
सभाभुउउउि, उथानकिक्तिनेनभाकुसंपविउभिकविक्तो, उथाकु
नंलक्तपामसंमातिभमितंपिनकूतीउ॥ एवभ्रुक्तिपयप्रतीकुउंभ्रम
नानतृक्तकूजा, विषयकालविधानाप्रःप्रूतिषुभ्रुनंत्रुतत्त्र
क्तपलवाप्रलपः, उभाभृक्तानंनिभुभ्रुनंपदृतः, विस्रुभजानं
पवक्तभकाउः, उथासेकुमंवासे यसोपलापः, सातुःमिवःभ
वतेभकाना पश्रभेयोक्तनतूनमवष्टाभीभकेभुउउि, भावम
कनभाभू, पुक्षावजेतनंनःमतिभिवउया॥ प्रवाष्टङ्किष्टा
भिवकाधयेउउतेभविमायिउः क्तनक्तपवभकुतेन, यतु
पत्तुपमभपैक्तनक्तभिकोउिक्तनउपंउमनुउष्टकुभिकायंक्तष्ट
कुपमृत, उभाउभवृताउकुभिकायंपलभक्तायंभकाउः॥ उभा
पिक्तिक्तिकिमकेविषुतीउ नक्तंमकेउिकिभिउभवापवाउिविक
भुः, याःपिक्तिवभूतुउःप्रभभपतुकमिकाकुकी, वडिकमा
मिपाउिवजिउःकमाकुपिपभुउमुउ, उनुनाकमतिनुविलानत
उपकेकुउि, उमिक्तपभाक्कुवपतउिः, मम्रमतिउभपा, वामक
पत्तृविभुगावलपवभतुउपनाभिवउ, भष्टभभपृतुकुपः
भवनुउकीउपेपिरकिनातुष्टापकप्रताकुपः, उक्तिसेषक्तनाक
विकुयाभलीचवामनलपवनवलिउः, कञाकुरभुलेभञ्ज
ङ्भीतुयनमः कलउउकृपवनउभ्रावेविरुउउकुउभ्रूनिञाल
कुतिविक्तभुपञःउकीयपदृक्तुपः, यउ, क्ततउनदृगभकुउःका
लेतृमतिजेकिः यउःपदृक्तकेपतुमारुलउात्रिभुकवीसीउि

[illegible]

[illegible]

यथाम्नृक्तिः भविसुवीलसृ भगामिवद्दनेनास्पृ ध्वाविस्रऽउ
उम्नयुपेद्दातिप्ान्मितिधाः भगः ॥ ० ॥ उक्तम ॥ मग्रीवि
भभयेभवूनेनामभविदृप(उ(मनु ग्सिनमधृभृ) लनधा
नेऽननमेउनकातेतऽः ऽच्छमनु ॥ मग्रीधभयेनातुभवूनेन
भीलनयानामस्रृ भगामिवद्दृविद्धः पद्मान्नपऽऽयाुवस्तुछ
वीसुरः, मग्रहुउऽवनातुगीयकः धूल्ल्नुऽः, उभ्यूत्राषि
ध्विउविद्धउधामीसुगभ्धमेउनकदूकऽच्छाप्रवकविस्रम
गः, उदृनामयुधुपद्दधूकामेकवपथः भगामिवद्दूगकद्द
नातुगीयकेविभज्ञग्मुगेवद्दः, भधूहायाउयाद्दा, मिच्छा
ऽद्देवानन्नः, धूल्लुद्दवाधानः पुंभेवाधूयाने, यथालेकेस
धानयाधुउः, लगाविभूल्लमाुप्रः भेभनुधउः, उथामायुये
नागृविद्धः यगीतवेनलगाद्दूच्छिउद्दके उः, गवभग्रीवि
भाधुलवृभतिऽच्छाप्रवकस्नेउनकदृकेल्सुरः भगाणदुः, ऽ
नधनीच्छवेधामानेनउध्रुक्रभ्यूनवनमनन्कृउनिवद्दुऽ, किमना
यंभेसुनमाचाकमविद्यावद्दभेविसुधाऽन्ठवेद्देनुवधूल
यऽद्दसुरः भगः ॥ ९ ॥ उभवद्दुभान ॥ भापगतुभ
भकुननभद्दुतेगुरदुभवामिऽुपाद्दकेवव धनन्कऽच्छामि
मकभभद्देऽभउक्ततेमध्वधेवव ॥ भकुते गुमद्मउलेभाप
गउंगाेवुंउथावाद्दुयउच्छ्राः, उथापाद्दुकाद्दान, ववभ्यंमक
लनिउेवेविभिस्रंच्छुनलऽद्दूचंधूतिविधुद्दुन भद्दुतुं नधूद्दुउ
उथामायुयकुउाकामच्छिमकामयु धूतिविभुपि धूवेवगेकिउल
उावयउः, धननक्तभिऽच्छामितुभः धूलीनः, मित्रनृद्देवच्छाधू
भृदः भभति, नलाद्दूुउाकामेविभेलनुउमित्रक्तेवद्दुापक्तुपीति,
यथेकुं सीविऽनक्तेव, निहेनिनगमूयसुदेहायककलनेद्दु
उलाक्कुकामेभनः, क्विदुधानाकामंभेभापवेमीमिउ, लाक्कुक
मभायद्दुल्लधाकामेधमनभद्ववक्तः, उथाधिनभवेधद्दुउ
पक्वाद्दुनुकेयलाधि(उंमकः, याग्वभायान्लयस्राभुगव

भ॰ त॰
पू॰
७

भद्दुातिल्लऽतिविवृद्दाविमेधनियुतिुउद्दु धूद्दुउमद्दुातुकद्दुव
नधः, यऽयभ्यद्दुउद्दुउवेमेमभ धूवेविवेधनक्तिउलगऽद्दुवं
नवाउ, ऽउंयद्दुद्दुापंभवधमेविमिद्दंमधल्ल धूउविद्धुउ, उथा
मिगोवंउलयाधुनउ, उथावाद्दुधाद्दुमाउद्देवद्दुीद्दुयवे
मुधीमनामद्देधूउविद्धुउ, उथाधनभाकामधद्मद्दुमाकेम
पद्मद्दुनद्दुउाकामेभद्दुवनीयाः ॥ ३ ॥ मथउाभीसु
भूलद्दुयाभान ॥ भेऽच्छाधभद्दुवकाद्दुमउद्दुलय
भगाद्दुवाभलगीधामनद्दु ऽच्छानउनद्दुयेनिद्दुलयद्दुव
वऽनद्दुभनद्दुउभयद्दु ॥ ऽच्छायाः धूभनयभ्यद्दुऽच्छाधूम
गः, ऽच्छाधूभवद्दुाउल्लभीसुरः, मकामद्दुउद्दुलः, यद्दुामृीव
भाद्देधुउवाकलूः, उनद्दुउद्दुनधाद्देविवीच्छाभधमयः
लवंविसुनिमल्लधकाल्लभिच्छाप्रवकमेवद्दुनेनिद्दुलं, उभ्य
मेवभनद्दुउाद्दुवऽलद्दुीउद्दुद्दुाद्दुभाउद्दुवः धूभवनः भद्दु
क्तिउः मकाणद्दुविभद्दुवेविसुंपद्दुद्दुकेलगामिद्दगभद्दुमा
द्रुमः धूथभभाविद्दुउः, उथामनाभविवउ, भाद्दुकाउद्दुल्ल
धद्दुउ सुमिवलः, ऽुपविवउेमाुवधद्दुपः भामवेद्दुवयथाकाना
वविसुधभाद्देमिकोतिः, भामवद्दुाधकउागिसुभा, उद्दुाकु
उद्दुकलामिच्छुउभ्यविवयथानिधीउः, ऽमद्दु सुमावद्दुमिनो
सुीवउंवाभाधूकीउिउ मद्दिकावाद्दुद्दुउद्देधुामेवायुपं
भ्यउऽद्दुनायुभद्दुमा भधूमनयेवथाुकभायं, लवं
ऽच्छुभानुमेवल्लगाद्दुमाल्लधाविकाः, नलाद्दुगवामिवद्दुक
द्दुउधूताउः, लवाभिच्छुधकाल्लविसुकउुविसुनिमाल्लधाउसु
भद्दुउाल्लनीच्छाकालेभ्यंऽद्दुालभद्दुाउ, नमद्दुउभद्दुाना
द्दुायवेधयेगंद्दुद्दुभ्यविवद्दुयद्दुाउेयउेनिकधामनवेसुगीभ्य
द्दुः ॥ ८ ॥ मथद्दुक्रेभलायविद्दुउंकुउभ्य द्दुवनिद्दुप
यति ॥ उद्दु सुमिथ त्रउनगनउउमूयेउभ मद्दुल्लनधवनाली
द्दुभ उक्यानिधीसाधावउवधयभेउभालिनद्दु सुद्दुागलीउ
भ॥ ॥

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

No. 795

[illegible] ॥ ३ ॥ [illegible]

[illegible] ॥ ७ ॥ [illegible]

३०

[illegible] ॥ १ ॥ [illegible]

[illegible] ॥ ३ ॥ [illegible]

[illegible]

[illegible]

[illegible]

RESEARCH LIBRARY
MS No. 795
Date..........
J. & K. Govt. SRINAGAR

[illegible]

[illegible]

[illegible]

[illegible] ॥ ०० ॥ [illegible]

[illegible] ॥ [illegible] ७॥

[illegible]

[illegible] ॥ ३ ॥ [illegible] ३॥

[illegible] ॥ ८ ॥ [illegible]

[illegible]

॥ [illegible] ॥

[illegible]

म० ७०
५
१७

[illegible]

॥ [illegible] ॥

[illegible]

RESEARCH LIBRARY
MS No. 795
Date.............
J. & K. Govt. SRINAGAR

NATIONAL MISSION FOR MANUSCRIPTS
MANUS DATA

S-605

DSO 000015619

Record No.	Organization / Individual 5619

Name of the Institution: Oriental Research Library University Campus, Hazaratbal, Srinagar. Personal Collection: α	Communication Address: Department of Libraries and Research Municipal Complex, Karanagar, Srinagar.

Title of the Text: Mahānaya Prakāśa Other Title	Bundle No: α Acc. No./Manuscript No. 795
Author: Siti Kantha	No. of Folios: 30 Pages: 60
Commentary	Size of Mss. 23.1 × 16.5 cms Material: Paper/palm leaf/birch-bark/cloth/leather/others
Commentator	Missing portion: No
Language: Sanskrit	Illustrations: No Complete/Incomplete
Script: Sharda	Condition: Good/bad/brittle/worm eaten.Fungus/Stuck
Date of Manuscript: 1694 Century Between [Seen – Last pages colophone]	Source of Catalogue: Descriptive/Hand list/Alphabetical/Index card
Key words	Colour of Manuscripts: cream
Subject: Saivaism	Remarks

c-by

22.10.05